
कविकुलगुरु - कालिदास - संस्कृत - विश्वविद्यालयः

४१६ भ ४३

श्रीगणेशाय नमः॥ विघ्नध्वंसप्रणम्यादौ शारदां च
सदैव सांबं दक्षिणामूर्तिं सगणं गोपालं तातादि वा म
निलं॥ नानाग्रंथा सम्मालोक्य गणकानां तु ष्ट
ये करिष्ये बालबोधाय ज्योतिःसागर संज्ञकं॥
अश्विनी॥ भरणी॥ कृत्तिका॥ रोहिणी॥ मृगशी
र्षार्द्रा पुनर्वसू पुष्य आश्लेषा॥ मघा पूर्वा उत्त
रा हस्त॥ चित्रा स्वाति विशाखा॥ अनुराधा
ज्येष्ठा मूल पूर्वाषाढा उत्तराषाढा अभि
जित् श्रवण धनिष्ठा शततारका
पूर्वा भाद्रपदा॥ उत्तराभाद्रपदा रे
वती॥ २८

१॥

ई सप्तविंशतिनक्षत्राणि ॥ विकंभ ॥
प्रितायुष्मन सौभाग्य सोभन अतिग
ड सुकर्म धृति शूलगंड वृद्धि ध्रुव्याघात ह
रखणव ज्रसि द्धि व्यतिपात वरयान् प
रिघ सिव सिद्धि साध्य शुभ शुक्ला ब्रह्म
ऐंद्र वैधृति ॥ इति सप्तविंशति योगाः ॥ अ
श्विनि भरणी कृत्तिका पादं मेषः कृत्ति
कानां त्रयः पाद रोहिणि मृग शिरार्धं
वृषभः मृगशिरार्धं आर्द्रा पुनर्वसु
पाद त्रयं मिथुनः ॥

१॥

॥ पुनर्वसु पादमेकं पुष्य ज्ञाश्लेषान्
तं कर्कटकः ॥ मा मघा पुर्वा उत्तरा पा
पादं सीहाः ॥ उत्तराणां त्रय पाद हस्तो ची
त्रधं कन्या ॥ दा ॥ चित्राधं तीरि विज्ञारवा
पाद त्रयं तुल्लः ॥ विज्ञाखादमे अनु
राधा ज्येष्टांतं वृश्चिकः ॥ मुल पुर्वाषा
ढा उत्तराषाढा पाद धना ॥ उत्तराषा
ढा नांत्र यपाद श्रवण धनिष्टार्धं मकरः ॥ ॥
धनिष्टार्धं ज्ञात तारका पुर्वाभाद्रपद

॥५॥

पा द जयं कुक्ष्मा ॥७॥ कुवीं काद्रिपद्यापादमेषे
कुटला व्याद्रिपद्यरेवसतां मिना ॥८॥ इति राशि
मा: ॥ चु चे चो ला अश्वी नी ली लू ले लो भ
रणी अ ई उ ए कृत्ति का ओ वा वि वु रोहिणि
वे वो का कि मृग कु घ ङ छ आर्द्रा के को
हा हि पुनर्वसु हु हे हो डा पुष्य डि डु डे डो आ
श्लेषा मा मि मु मे मघा मो टा टि टु पूर्वा ११
टे टो पा पि उत्तरा पु षा णा ठा १२ पु षा णा
ठा हस्त १३ पे पो रा रि चित्रा १४ ॥ रु रे रो ता
स्वाति १५ ॥ ति तु ते तो विशाखा १६ ना नि

॥३॥

कु नो चं १७ रा धा १७ नो या यि नु ज्येष्ठा १८
ये यो भा भि मूल १९ भु धा फा ढा पूर्वाषा
ढा २० भे भो जा जि उत्तराषाढा २१ जु जे
जो खा अभिजित् २२ खि खु खे खो श्रव
ण २३ गा गि गु गे धनिष्ठा २४ गो सा सि
सु से सो ता शतभिषा २५ सो दा दि पूर्वाभाद्रपदा २६
दु ञ झा था उत्तराभाद्रपदा २७ दे दो चा चि
रेवति। इति अवकहडचक्रं ॥ दस्र १ यम २ अ
ग्नी ३ ब्रह्म ४ शशि ५ रुद्र ६ अदिति ७ जीव ८

सर्पः पितरु २० भग ११ अर्यम १२ सविता त्वष्टा
यु इन्द्राग्नी १६ मित्र इंद्र १८ पं रक्षो तोय २० वि
श्वेन ची धी १९ वसु ण २५ अजपाद् अहि बुध
पूषा ॥ २२ ॥ इति नक्षत्र देवता ॥ प्रभवो विभ ॥३॥
वः शुक्ल प्रमोदोथ प्रजापती अंगीरा श्री
मुखो भावा युवा धाता तथैव च ॥ ईश्वरो
बहुधान्यश्च प्रमाथी विक्रमो वृषः
चित्रभानु स्वभानु तारणः ।

पार्थिवो व्यययाः॥ सर्वजीत्सर्वधारी च वि
रोधिविरोधीवी वि. कृतिखरः नंदनो विज
यश्चैव जयो मन्मथदुर्मुखा हेमलंबि विलंबि ल
च विकारी शार्वरि प्लवः॥ शुभकृत् शोभनकृ
क्रोधि विश्वावसु पराभवा प्लवंगः कीलकः
सौम्य साधारण विरोधकृत्॥ परिधावि
प्रमाधि च आनंदो राक्षसो नलः॥ पिंगल
कालयुक्ता सिद्धार्थी रौद्र दुर्मती॥ दुंदु
भि रुधिरोद्गारि रक्ताक्षि क्रोधन क्षयाः॥

४॥

इति षष्टिसंवत्सराः ॥ ब्रह्मणो विंश-
ति स्याद्द्वितिया विष्णुसंज्ञिता ॥ रौ-
द्रिप्रोक्तोत्तृतिया च स्वनामसदृशस्म-
ता ॥१॥ विज्ञेयाः ॥ मिनाकी च द्वे द्वे रा-
शि वसंत ग्रिष्म वर्षा शरद्धेमंत शिशि-
राः क कीर्त्यामय मर गौलरं ॥ इति ऋतुः ॥
चैत्रे मेषकुळि विष्या वैरा रेव च पना

४

गर्भं ॥ ज्यष्ठमासे सर्वेभ्यः आशाढे पशु
नाशनं ॥ श्रावणे च न ब्याधिरस्या ह्लेशो भा
द्रपदे सर्वे न आश्विने कलह विध्यैका
र्त्तिके मत्यु मदिरोत ॥२॥ मार्गशिर्षे च
ने प्राप्ति पौषे च सर्व संपदो ॥ माघे चा
ग्नि भयं विद्या फाल्गुने मरुतक्रायं ॥३॥
दिर्घलिंच पथ हेम्न गुणये देष छत्र पति ट्टौ
त ॥ विमतं तलिहे रसै श्राच्चु आदित्य पउ चय
तो ॥ मा

॥५॥

धजोघुमोवृः सिंहाश्च वृषभश्च अवृ वस्व
स्य स्वरे ग ज्ञो ध्वं ष्टि चेव क्रूमे ठो वृ म ष्ट कु
मुदाधृ तं ब्र स्रण स्य ध्रजो होयसिं हो वेकु
त्रियस्य चः वृ शना श्चैवे श य स्य स स वें व फेग
जामूतामिता नगरं हं वक्ष्मीके पूर्वे घुमे मिनक्षा
यं कावे त्रा कन्यायादक्षिणेनागोमनरू
लकष्ट कोकिताना पश्चिमे च क्षायं चन्वी
ना यव्य नवसेतुश्चे उत्तरे नवसे मेषे ई गान्या
[illegible] विनस्यति ॥५॥ वृषभोमकरस्तुगमे

॥५॥

९

सिंहे चैव चतुर्थके ॥ मध्यस्थाने भवेद्भृ
गुः ॥ अन्यस्थानेषु खंकावेत्र ॥ १ ॥ मिथुने कै
कैल व्वि निष्फला दृढ र मेद्रु नदा हुः य मेदा
रं मकरमिथुनयोरगनायां तवौ वः ॥ ८ ॥
वेतौ लीवाटचरव बच्छिमे द्वारमुत्तसिंहमेव
धनुर्षीघटद्वारमिथुंकंतदा हु ॥ आमुखे वैकेंदी
कु चत्वारि चत्वारि कर्कमेव चाः केंद्रा त्रि
णि मुदे त्रितिरव्यादिस्थापये क्रमात् ॥ ११ ॥
मुखेन्दु स्वामिनोमत्यु पुनेउद्योगमेव चा ॥

दक्षिणे चार्द्धकालाश्च यपश्चिमे संततिच्छु
वंगवया उत्तरे हृनीरोरूक्षगंको गवौथि नश्या
चिरकालेन से कोटे ॥ गुदेमारोग्यजायते ॥ १५ ॥ हो
रं काप्राविशादिकर्म खेनं प्राविशत्ता इति कु
ल शाव स्तु त्रिवेदाच्चीत्रिवेदान्वीदीत्रिके आर्वी
न्य शास्ति ॥ छिद्यद्दा सास्थिरंज ॥ छिम चुरिंद्रं चपना
गरुशा ॥ ७ ॥ भयाधिम्ह मनोयं कयोप्रवेशार
णयोश्चबद्धति वृषजकाम्रु ॥ त्रिकं त्रिके च
सत्रिन्यां कन्याद्विनां ॥ स्थिते खोप्रवीदिच्छिन कर्त

वैद्यं रो द्रौय था ज मं ग २ पा आयुतो हरति
आयुपुष्ठ तो हरति घ नं का म द द्धा त प्रो क्षे
सर्व का म फ ल प्रदं ॥ श म धा म गं सि
रो हस्राखी मुक्त न्तु गी प यो ग रवति सा हि णि
ये व तु न रा णां त्रयं न चा ॥ आवाहे ऽपि का
हि शु कन्या सं व र णे शु चा ॥ ना प मे ल स वं वि
डा नि ग ह गा ॥ मे प्रवे श ये ल गा ना स्तु चं त्रं प्र
व च्छामी म हादेवेन भा षी तं य स्मि स च
र ते भा नु ते त्र दो त्रि णि म स्त को ॥ ॥ दे ढे वे

॥ ११७ ॥

पादयोः श्चैव स्थापयेत्रिणि पृष्ठतः दद्या
चत्वारि दक्षिणे ॥ भा प्रदद्यात्त्रीणि पृच्छे च ना
सिकायां द्विनी यत्नतः ॥ नासीकायां श्वामी
मोक्ष सु रुद्राक्ष चा ॥ पादयो ॥ द्या ॥ गर्भिरोग
भयं पुच्छे याम्ये चैव घ नाम्नं ॥ ११७ ॥ शेषे पु
छेकावेल क्षमी वास्तु सारमिदं मतं ॥ न तोई मा
दिकार्येषु वास्तु चक्रं वीलोकयेत् ॥ इति वास्तु
चक्रं ॥ इति ज्योतिषी सारे गृहारंभ प्रकरणं
॥ ७ ॥ अथ मंचनायं लोगं ॥ का गंदेयां के प्रांपि
डा स्कंदु ष्कं ता नं विपतिजन्मतो रवि ॥ ५

॥ ७

मन्ना नी चां सुखं रोगं हानी लाभं धनं मृत्यु
आयं श्री स्वं धनं रोगं ॥ जन्मरो फलं द्वादशा ॥३॥ य
भयं हानि धनं वैराग्य सुखं लाभं जयं मृत्यु पा प
सौख्यं धनं हानी कौमा जन्मा द्वि रोग वि बंध
न भयं द्रव्यं नाश ला भ कार्य सुखं रोगं सौख्यं
धनं मृत्यु भ मासे स्ये फलं प्रदा ॥ भयं द्रव्यं
नवे क्लेशं हानि सौख्यं धनं गन्नां वृद्धि गुदं लक्ष्मी ८
पि डा कार्य ता पूर्णा द्व स्या: भाग लब्धि सुखं लाभं भु
चोन्नतौ र सु चंच धनं नन्द सौख्यं सुक्षं रोगं ॥ जन्मते
सुखं दोनम्ग भ्रमादि व्याधि विजयं वैर ना स ५

लाभं कलिमतिं ॥ जयं दुःखं धनं रोगं क्षमा
सौरि फल प्रदा ॥७॥ बुध शुक्रौ रवि मासं
मास सार्द्धं रवि सुता ॥ गुरु वीर्यी च सार्द्धस्या
राहु केतु स्तथैव च ॥८॥ वर्षसार्द्ध द्वयम
दो सौरा रौ फल प्रदा ॥ यवं गणाज्ञानि
ध्यो स्तु रश्मी च विचक्षणे ॥ ९ ॥ दाद सा
म जन्म लग्ना स्तरं गारको गुरु ॥ कुमंति
प्रान संदेहे दैवज्ञो या गं ध नं ज्ञो ये [illegible] राहु

केतुफलं सर्वं मंदवत् चिंतयेत् ॥ क्षितिजा
गते नेष्ट स्वेष्ट्यादि द फलं ॥११॥ प्रवेशाद्भौमे
मार्के भूकेन्द्योः स्त्रिसप्तम गौ ॥ नगछे
शनिदूचलवेदाफ दोत्कथा ॥१४॥ यद्देशो
नेशोशौचे नगहं संचरतेन्न पा ॥ ताद्दे
फलमान्यो त्रिभवाय द्विवा भम ॥१२
रतिज्यो त्त शौ सा गरे गो चरप्रकरणं ॥ २
रसाभुचेति छि चंद्र कुलष्ठा खण्ड चंद्र
जो ॥

17

॥१॥

दि मंदे के डजि वा कैंस कृष्ण ऐक मिंत्रा लि ॥१॥
ज मे रासी ज ते राधा द चाद्वेवं क्रमा दिमातु
तुजा न श्रु कामो ताश्रुवास्य तोमरस टजा ॥
दलि गुइदेगाः आस्मै नानि श्ररति चक्र गतेल
दर्दं चधा रिमा ॥ ह्विणा करे धियुगे रा पादुरे चल ॥१॥
सिव मकरे गा व्यु दरे च पंच मघ्यो च जर्थे न य
नेयो धिरायें कुदेवेः रोगोला ना म्रवा दाद्वि चेगे
यं ला वे लै व चा पुजा च धनासौ स थ स्थ प
स टं व्वों क्रमा त्यो ईला राति फव्वों ॥ ददया सि
र च त्व रि दो ह्वि णा करे ये क्कं र म स्वेप
चम ॥ ॥ पाद मो वट प हां पयेल ल्पा ॥ करे वा मो

य चवा रिश्रि णोदधाच्छ्रने त्र पोगुरु ना च फक्केइ
यं क्रमाचैवं भुक्ता श्रु नां ।। राध्यं ना हिम घ नो प्रि
लि पि ज्ञम्न्यस्त च्छिवचरक्तु रवचैव क्रमेणैव फ
ल प्राप्नो वीचक्षा नैई स गगुरुः ।। उ श्वा ना क
र्म कर्तीवैं स्यात्तो पुण्य पुन वीस्त्र धनि श्रा द्वि लिय
ठ सो रेव तीरो हिणि दयेः ।। स्थानं ध्रुवे शाव
म नं प श्रुनो चैव कर्त येत्स्याद् वशात्स्यो च र
तु देवस्या ध्रुवे श्रावणा चित्रयो ।। ९ ।। सोभार्क
वे ध्रु ते पातोलग्ने पं चन नेपुष्येः ना स्त्रवं क्रांति
ति क्रांत्यु प स्तु यं न कार येत् ।। कृ च क्रे र न स्य
सिर गुणा स्तु र व करा रा गो मृ रवे मा ण दः ।

१० बाणौ वै उदरे सदा दयवरा पादौ गजाननं गदा॥ १०

पुच्छ कंन्ना छिन्न द्वैच नश्वय करापश्चैवं सि

विप्रहा हं सौख्यं निरोगनाथ को निंगादि ता

इ चैव सतां नग नवीधि नवा ईसिध च जं भवं वेषु

लावं दशा पश्चलावं पुछाद्वि ना रो चरणे घी

लंगं नटु देपुना वांवहु नो छिला लें ऊभयस्य च

कैरवि काछुणोंडा ईसिपा रश्च च क्रेता॥ द्वौ म

दे सिद्दिल गेप श्रुनन्न प्रवे शा नं सो मे ला

मा वघे गावो न चाल्यात्रु मगा गा नौ ताब सा

गौ या ह चि क्रमो काय्यौ हा सेमे त्र त्र यो बर्के॥

उपादि लाघ निखातं यदूर्ध्वेऽर्वोगये तथा ॥५५॥ मध्ये
निर्गं यं कार्यं गौ वा लोके विशेषतः ॥ शनैश्चरे
च केंद्रस्थे वसरो छेस्तुनाशापि ॥५६॥ हस्ते च
चित्रा स्तनपाश्वनिस्तु स्वातौ च पुष्ये च पुनर्व
सु चैत्रे तौ निरवर्व्यापकुजराणां कार्या
णि गर्भमुखो निस्तुतानि ॥५७॥ इति ज्यो
तिरसागरे पश्नांप्रकरणं ॥ इष्टयाम
मान्यं स्य द्विलिष्टान्ु राचयो ॥ उष्टे पुनो

।४०।

सुहस्रोरेवसो अवजेगे श्री दिंत्यायाम्यप्रापश्चिमो
दिचि दिक्षुया ।३। विवर्जयेत्: पूर्वान्नाद्र पदाजी
सूरानीक्षिन्द्युत्तारफलजुनी ।१३। कृती तिनक्षत्राङ्क
के: सम स पूर्व चान्नो विशाखा च ज्ञुसहस्तौ
मतौ न ज्ञा आग्नेय वायु दिश्ववेये परिघा ते वल
च येत्सा ।३। इति परिघशाचक्रम् ॥ नै ध्रुवितिया
च चतुर्थी वृष कुंकायो: मेश क कीटयो ष
ठी कन्यायुग्म न व्याष्ठमि: ॥ मादशमी वृश्वी
के सिंहे घादशी मकरेत्तु वेत् ॥ ज्ञातव्या दि
क्षियो दग्ध्या बोधोरारि ॥ छि तोर नीपात ॥ इ ति
दग्धतिथि ॥ ॥

।।४५

यथां नाशिवैचबुधेरानोगन्दुदीशिकु
नुव्कं:गतिवियपक्षंरगुणिना:सपुकिसे
वर्गङ्लितापुक्त:गस्पुरदारावहिगुणिता
वृलकिश्रीवन्याङीरद: चतुर्गुण्यांनिजा
त्यग:आश्रीनानियथाक्रमत:पिंडस्या
सवमेश्नुन्यमध्यश्नुन्येमहाद्यवरात
असंश्नुन्येरामरणंत्रिश्नुन्येरहिरंश्नुना
:र्द्दीित्रंक्र: नंहुन्नद्राज्ञयारिक्रापु
पंक्तिस्पृरिथेयंकेमौरेग्गुकैनोद

५२

माछ कृत्तान यस्यातिमे कंदुन्व चयेछ
विःव कृतं चेतराला द्रपदा चयमदेव
तः। एोहि ठि रुद्रकांस्मार्पमेवादिनाच
दमकोगास्वे बश्रुका कार्यी श्रुवर्जनियप्र
मलनाः। ईतिपुत चंद्राः नयाम्य। गुरौ
गढनो हि च्याक्षुपक्योमयोः। श्रुकाके
योनप्रती च्यानप्राच्यांवा निसौमयो
।।१।। इति दिकश्रुचं।। दयादग्नेनानि
व कैश्युक्रे दोनेव नैस्तो। कडेनगाखेद्व

५२

सदाद्वप्रहराख्याज्या वारेश्रुतपनादिषु ॥ यचो:
क्रौमेचरनु: ४ सत ० द्वी २ पु च ५ ष ८ [illegible] मीता: ॥ १९
वाराद्विगुणितमंदजौमहोऽन्तुरपुञ्जिते ॥ बुधिकेकेटः
कंकाळिवेळास्याघनघंदक्रा: ॥ इति यमाहंबुळिके ॥ १२
कें टकाळवेळा ॥ सुर्यभा दुगी [illegible] द्वै सप्त [illegible] गमाद्दि
रे ॥ त्रिषद्खमनंसैव [illegible] सप्तमहतीडळं ॥ १२ ॥ प्रथमं
पंचवचारि आडेळनो [illegible] त्रिचतन ॥ षा ना यां वर्ज्ये
पनादाड ळञ मणन पे: ॥ १२ इति आडेळे ॥ त्रमणंमेषेच
[illegible] पुष्यलागे वृषचवर्न्नाम चरे [illegible] म्यो ॥ सुगमे

१३

पुष्ये चन्द्रामं दहरि ज्ञोक ज्ञोऽयः ॥ ४२
पुर्णा रविरवौ सर्वकार्यस्य सिद्धिदाः ॥ १४
क्षोमार्किवारयो नन्दा कन्द्रा दिव शार
क गो: ॥ पुष्ये जयाकैगौरिलाशानौ पुर्णो
च चम्भ्रसुदा: ॥ विज्ञारलादि चन्दुष्टे केवा
स्वरादि क्रमेण न्तुः ॥ उत्पातकाणास्या
सिद्धियोगा प्रकीर्तिनः ॥ बहा ॥ रू पुष्यो
विवाहे चानि गमि त्याजिरो ज्ञि जिनौ भौमा
श्चि निप्रवेशो च राभ्रा सौं मरणायवै: ॥ ४७

१५

[illegible]यघटपश्चमायंवृ[illegible]ष्ठे भिनेचतश्चोतरायां
नैऋत्ये भिनेचतेथो सन्मुखेसु पल्ला[illegible]नायदक्षी
णेसुखसंपदा ॥ पृष्ठे चमरणं चैव वामे चंद्रे धन
क्षेया ॥ इतिदिक्चद्रा ॥ ॥ केमास्तवीत राग्नुच्
नैऋतिया स्यप श्चिमे ॥ वाय्ये राल योगीळैने
वप्रतिपदादिषु ॥ २४ योग्नीनिदक्षीने योगस्य
टिस्तीधिप्रजायते ॥ सर्वसीधिकरपृष्ठेहानि
वामेत्रितालयें ॥ २५ ॥ इतीयोगिनिचक्रो ॥

॥१४॥

र वौ नु कै बुध चंदे मदली च मंगळे ॥१८ निप्रति
दिने होरा हि ॥ यास्ताद्वै द्विना डिक ॥१९ यस्म ही
वासरे र्थे च प्रोक्त मुनि भि श्रुवे ॥ तं का र्य त
होरा या हत लर्व पू सिध्य ति ॥२०॥ इति
होरा ॥ प्रवेश निर्गमो नष्टो निर्गमा च
प्रवेशानं ॥ नष्ट मेकी कृनेत व्यं नसु स्थो य
दनं यता ॥२१॥ आ दि लेचा षष्ठ म दल अष्टौ

॥१४॥

त्रिचोत्तरात्रयं ॥ मृगपुष्य च धनिष्ठा च सि
द्धियोगा प्रकीर्तिता ॥ २८ ॥ सूर्यो विशाख
भर पिद्वादसि च चतुर्दसी ॥ अनुराधा
मघा ज्येष्ठा विरुद्धा सप्तमी सदः ॥ २९ ॥
सोमे च नवमी पुष्य श्रवणे रोहिणीम्
गाः ॥ दशमी च तथा मैत्रे सौ सिद्धि योग
प्रकीर्तिता ॥ ३० ॥ चन्द्रे च चोत्तरात्रा

॥१४॥

दा कुर्वी श्रावण द्विदेवतें॥ राष्ट्रे योदसि चै
कादसि चैव नानाभौ त्रैयोदसी वैष्णिच्चया
या पितृन्ना॥ मुक्तां ख्रि निमग्गक्लोबोत
सक्षाद्रुपद ग्नि कों॥ मूरक जैवाद्रोप णिष्ठा
चप्रतिप्रतिमल पुर्वीनाद्रूप का॥ सोतता
रोते स्वश्रा दरा ग्राच्य विवर्लेय॥ ३४ बुध
वारे द्वितिया च समाप्ति॥

॥१४॥

दाह त्रीनाया ॥२८॥ गान्दर्शना पुपुष्प
चहतिरतिकारो रे जिनत्वा पुष्पाः ॥ दवदि मुच्छ माध्व
चूधेचि दुधाजारति चैव प्रतिपस्त्रु
नः॥ वदियाननगामि वारविशख्या चपु
ण्णाव हा॥३९॥ जुस्वाके च दृष्या नुर
णाजैव रिथिमाया॥ क्रोवे स्तुजा जवेष्णि
पाचाशिदिपुष्प पुनर्वे स्तुजा ल्याति ॥ जी
चलि चत्ति चो गरपालु
रन्ना चवाकर्णान पाद तिकमादिति
...मा॥३॥६०॥

शुक्रे च प्रतिपत्षष्ठ्येकादशी च बुधे च
द्वि॥ रेवति चाश्विनि पूर्वा श्रुति मैत्रा
दिति उत्तरा गुरु कृत्ता॥ भरणी रोहिणी ज्ये
॥१६॥ ष्ठा दिति यात्रा सु हमिता धाः॥ पुष्य मूलौ ष मृ
गा वै जयाद्याः सर्वे शुक्रमेले॥ ६॥ ज्ञानी ॥१९॥
चाश्विन वासि अचयुर्ददृशी चित्रो हि पो
ष्ठा वपे च मघा स्वाति पूर्वाफाल्गुनि सिद्धि
द्धिदाः॥७॥ स्नानौ च सप्तमि च जाषष्ठि वो

चौ रा र फाल्गु णि ॥ पूर्वा षाढो त्तराषा

ढा ॥ साभ्या हस्त चरवणिता ॥ स्याद् द्वस

पी योगो ॥ अयो गो सि द्धि योग ॥ ह्र वृद्धा

वे तौ त्त वतोय हि ॥ ॥ अयोगो हन्त्यते ॥

सि द्धी योगं प्रवर्तते ॥ ॥ भु ॥ शपुष्य

रविर श्वे पूर्वा क्ष्या दी ति योक्ष यो ॥ ॥ र्णा

नुत्तिश्चा ज्ञा वा योग स्याभ्रि मघा युगा च

पंच मि ॥ रतिय मा नुराधा च नवम्यां

चतु रसि का ॥ स्या ज्येष्ठ मि मे हि ति

९१

॰ के॥ योगो ज्वाग्गामुख्या त्रिधा त
सो ज्योयं शुवाकार्यै भ्रवद्दृत्तोच्चि
शुकोऽह्मा॥ स्म मघा द्विदेवतो सौ
वं मूवं कारिनेवद्भ यं॥ हस्ता श्रे सा
वराद्धतौयमधंष्प्र किर्तिः॥ त्रिग्गा त
तिथिकृ तमां हो पकनंद वातांति मू
द्वि १५२ विव॥ द रो १०ग० वे दृ४ सा
त्वा॥ अ यमे॥ क्रागनवनप चौ

१०

पंचमस्स गाथा तत्र सकलावलि ~~सव्वाव~~ परि
हार्यं पंचके पंचके क्षु ॥ गाथा प्रकाराद्वे नरस्या
गता तिष्ठ त्कलगं नवलिखि वर्ग गमा हरेन्न ॥
पंके सेम्य दर्शिश्र चक्र चौराजपंचका ॥ म
बहे चौराष्ट्र केरो गं पंचकानि क्रमेण त्रा
या आदि सर्जकार्ये भुवर्जन्म तिमाल्ले रा ॥
रवौ रोग कुजे वह्नि इत्यादौ चम्स पंचके ॥ त
वर्ग्ये चूर्णिनी ले चौरं नृपे वार च मृत्कर्द ॥ पर्व
... चौ स्याज्जे द्वाशो द्विवारा जागिन पंच

॥१४

उमयोसंध्ययोमस्तरंन्यकाळेनानिधनः॥छिर
सोवारा॥पच्चेचोरंचौरवहकनोग्निपंचकः॥
ब्रह्मेवधोसेजोहोगंविवाहमस्तू पंचकं॥छ
ईदीवंचका निंग॥मिनेमेवेचयुर्नोडपास्त्री
च्छववकुंजनयोः॥मकरमिथुनेपंचं त्रोवी॥५८
स्तादीपकिर्त्तितः॥५८ईतिलग्नघटिप्रमाणं॥
कलारप्राप्तविलग्नेवहोय्यचयुगीः॥५९॥क्ष
त्या म्मायां कर्मगौचौभौनैरुद्रषनवो
मूरु॥५९॥

श्रेति च सप मो मं दोवा यो वहस्त राशिगः
नीं कां धुः४ गो व्यथाः सौम्ये गरुत्वादसंघनाति
गः।पद्दाहीसि लका स्त्र ह्राः।धे मं कि रा सि
न कृदाः॥ द्विजु युक्व वैरज योलंगता लाव
श्रेरि ना च्या व्यं गै द्वा यमम मा श्रिमा क्ल वस्था
मौः।तं द्विकाम ते र वौ क्व य धुने मौ स्वं जा। यस्ये
दि नि भो क्षे कैं स्यातिला नप विष्णू वस्रभा।तु
अपध्याय वेः।पेशा या त्रा यद्व वि वाहे च
प्रवे शे न द्र प्रदि शुः।व्यापार च्छ चपं

37

व्याराहप्रवाद्ध्यचना॥ पन॥ इति पंक्ति माराह्र

घ ऋ॥ — —


१९

घ	र	घ	च	वै	र	अ	र	गो	च	श्री	या	का	र	मा	च	मृ	म
घ	र	अ	च	ज	यो	अ	र	को	च	ह	म	का	र	मो	द	घ	न
घ	म	का	च	क	ग	अ	र	मो	च	खी	ला	क	र	घ	च	सो	र
घ	र	मो	च	ला	ग	अ	र	घ	च	व	श्री	का	र	अ	च	अ	घ

जन्मऋणयेनदीदिनव्यै चैत्रधावनाः॥ नव
मिऋषरेवतगिं गो पंशादा॥ अनि ११ ज्ञोत
जो मतादि लि या च षष्ठि चैत्र चतुर्थि
का॥ ज्येष्ठमि नवमि तारा षदृ इति तानाः
॥

का	र	घ	पा	[illegible]
मो	र	गौ	च	[illegible]
मो	र	क	च	[illegible]
श्री	र	व	च	[illegible]

जन्मभाद्रपदे दाहो दिनर्वे चैव गावद्द्रस्त्व
वक्ति रूहरे कर्णां गं चौथं ता य विनि दिशो नराः
जन्मी स्तारा द्वितीये च पक्षि चैव च कुर्थि
कतार ज्येष्ठ मि-न विमितासष ट्ः दूर्ध्व नाम ॥
श्रावणा जायां गृह फ्लोग फाल्गुन्नो लभ्यश्च



तप्रमं ते पदो वृष श्रु शौच स
प्रमौठ्ठां यदस्थां जां तदा कालेय
त्राचैव श्रुवप्रदाः ॥ ध्वाजगतो
दश्य मध्यं ग्रोत्याष्ट चैव शाग्नि श्र
राः ॥

२०

लम्भोरविचयदाकृणांतदाया त्रक्षु व्यपू
दाः॥१२॥ लग्नरिक्षेष्य दारुणौ लना
श्रीदृक्सपमाः॥ ज्ञानमकुऋवृधाश्री
कोदन्नायात्रा ष्टु १७ प्रतः ध॥ लगोगर
यदालगुणष्टह्म यीष्टमाः॥ राशिभ
यवा नमं चं द्र हाद श्रीवं स्तुप्रदा॥१५॥
नटसाकीनारतोगछेष्यपतं दुमध्यको
निव्वा अंभाद्यधियवा न्माबा-नार

२०

स्तु ध्वनिवारणं॥ गणेशः प्रस्था स्य देगर्गो
शाकुनं च बृहस्पतिः॥ आगरमनातु
दगाहं द्विजाकल्याणनादिना॥११॥ द्वि
तिब्यो तिबसागरेयायाप्रकरणं॥
जगास्थितो द्विनकरकुरुप्रकरकुरो
महदरणः॥ कांजिकेदुवधूधम
रवकोंतिदास्युः॥ उरवावकाधनविना

चाकराः प्रशिष्टाः वित रिघन्नारविश
निश्चरस्तु भिपु त्रा।।च श्रे शुधारस्तु
स्कैग्ने दंनोवानना विघंघंन चञं
कुस्तेधनस्था।। आनुः करोति निरुजा
रुजानिसे विक्रिर्ति श्रायं द्वित रूपचुदं
रपक्षा वं रुक विररविजं कुति यं।। आदि
सनौ मारान यस्तुरवधजिन्नां कुर्वं
तिजना निनरं स्तुचिरं चतुर्वी।।

११२५

१५४

42

वामो बृध स्तु र उ दे हज अखं घिपं न्व
परत्तो यशासः प्रवृत्तिः ॥४॥ स्तुतो प्र चु
र कोपगतां वृधो प्रिनि या ता रिं शाति
घ यानुते कुप त्रंः ग चंद्रो गृक लुग स्तुतो
वा हु ङ्गामि त्र स्रो र व्या पिकं भुणो
रन स्तु खिनं कुक पाः ॥५॥ मा ते ड स्तुबि
न ऊ डो हि ना गो चू य क्षा पं वु न रं रि
फु ब्ट सरि वु ब नि य को व्यो ड जो मा रि

विं हि नमल्परोगाढ्ज्ञि वःकरोति
वि फळेषु रूषं शाचां कः।दमाति मं
षु कौ मरवि जाष्म्र कुलनसंख्या
जायांकुक मिनिरुत्तान ह्रुणातिचः॥ ॥१२
॥५५॥ सं ज्ञिवेडं ना।गे वधः बहु फणायतं
थ मान्वींतंजु नम नोधम हिं ख्याः॥ ७॥
सावें गृ लादिन करस्यभु स्वामि तीं
रस्तुक्षि नाविधे देन कि वदुषं दीः

…ति चानवशिपं हि न गाज यष्ठि
ष्या थि छि न मादी रो गगुलो रूपै नं
घर्म स्थि नार कि वानि अरसो मपुनः
कुर्वं नि धर्मे मि रतां जान धरि पूपंग
चं द्रोव घोन्नग कुयः श्रस्रेस्मंत्रिघ
मैप्रद्रा मनि टारां कृस्तेमन्ब धः ॥१॥
जादिसं न्तोमाः शानयाः किळ कक मै
सं रुवा कुर्यी बछु कु कमिक

रंदधिदं ॥ चंद्रस्याकि रिभिकुण्णो बहु
कुत्रसुतंच मैन्वीरं वधगुरुस्तुकाकि
मीणा डं:गाथा। लोभाश्रि दोदेना ॥१॥
॥२॥ परिनीय लाभारुवं नासयाद्रिवधिघ।
नं द्विति जा:।।

[OrderDescription]
,CREATED=18.10.20 16:03
,TRANSFERRED=2020/10/18 at 16:09:20
,PAGES=46
,TYPE=STD
,NAME=S0004142
,Book Name=M-1847-JYOTISAGAR
,ORDER_TEXT=
,[PAGELIST]
,FILE1=00000001.TIF
,FILE2=00000002.TIF
,FILE3=00000003.TIF
,FILE4=00000004.TIF
,FILE5=00000005.TIF
,FILE6=00000006.TIF
,FILE7=00000007.TIF
,FILE8=00000008.TIF
,FILE9=00000009.TIF
,FILE10=00000010.TIF
,FILE11=00000011.TIF
,FILE12=00000012.TIF
,FILE13=00000013.TIF
,FILE14=00000014.TIF
,FILE15=00000015.TIF
,FILE16=00000016.TIF
,FILE17=00000017.TIF
,FILE18=00000018.TIF

FILE19=00000019.TIF
,FILE20=00000020.TIF
,FILE21=00000021.TIF
,FILE22=00000022.TIF
,FILE23=00000023.TIF
,FILE24=00000024.TIF
,FILE25=00000025.TIF
,FILE26=00000026.TIF
,FILE27=00000027.TIF
,FILE28=00000028.TIF
,FILE29=00000029.TIF
,FILE30=00000030.TIF
,FILE31=00000031.TIF
,FILE32=00000032.TIF
,FILE33=00000033.TIF
,FILE34=00000034.TIF
,FILE35=00000035.TIF
,FILE36=00000036.TIF
,FILE37=00000037.TIF
,FILE38=00000038.TIF
,FILE39=00000039.TIF
,FILE40=00000040.TIF
,FILE41=00000041.TIF
,FILE42=00000042.TIF
,FILE43=00000043.TIF
,FILE44=00000044.TIF
,FILE45=00000045.TIF

FILE46=00000046.TIF
,